M. T. B. COLLEGE, SURAT

Manuscripts Library

No. Ref.
Ser. ९७९

Title: Batuka Bhairava
Tantra

979

	Field
Batuk Bhairva Tantra	Title
	Author
	Editor
	Year, Vols.
	Publisher
979 Complete	Remarks

॥ॐ नमः श्रीवटुकाय॥ ॥उद्धरं वटुकं दैत्यमापदुद्धारणं तथा॥ अष्टोत्तरं
शतं देवि बटुकं मंत्रमुद्धरेत्॥ एकविंशाक्षरात्मा॥ वाक्सिद्धिकरं परमं
तु॥ सर्वसिद्धिफलसंसिद्धौ कीर्तितः सुरपादपः॥ संयुक्तादेहनकेपुस
न्तेनत्वस्येदाद्यापुरा॥ म॥ आदिपंचकमाद्यै शक्तिबीजं पुरः सरः॥ व
कारं पंचकस्याद्यौ मीशानादि प्रयोजयेत्॥ षष्ठं द्वितीयं युक्तं यान्तकं च व
रेणवनद्धना॥ श्रेगाविष्टा॥ नियुक्ता॥ निर्णवाद्या॥ निकल्पयेत्॥ तस्य
था नं संधिमस्रोक्तस्या त्रिकादिह्नि मेदनः॥ ध्यानं॥ वंदे बालं स्फुटिक
सदृशं कुंतलोल्लासिवक्त्रं॥ दिव्याकल्पैर्नवमणिमयैः किंकिणी
नूपुराद्यैः॥ दीप्ताकारं विशदवसनं सुप्रसन्नं त्रिनेत्रं हस्ताब्जाभ्यां व स्ता
दे

बटुकमनिशं । स्मृत्वैवं दौदधमना । उभयजा स्फट ॥ २ ध्यायेद्वी ॥ अमालिनं
उपेन्मं त्वं ह्रविष्यासि जितेंद्रियः । तदत्र्याशांयजुकया । लिनैर्मधुरमं युतैः ॥
धर्म्मार्थमर्ग्दिहिः ज्ञात्पीवेपंकजन्नो जितो । षड्धाणं नात्रिकोणमंडले ।
मपंकजन्नो जिते ॥ बटुकं स्ययेद्देवं मूर्तिमन्नेनकल्पयेत् । मद्यो जाते
नमं त्रेण देवमावाहयेत्ततः । मूलादिवा मदेवेनस्थापयेत्परमेश्वरं । मूलमं बटु
त्रेण कर्तव्यं मान्निध्यां तदनंतरं । अघोरेण सुधीः कुर्यात् सांनिरोधमनंत
रं । पुरुषाख्येन मनुना योनिमुद्रां प्रदर्शयेत् । देवायवंदनं कुर्यादी २
शानेन समाहितः । एतस्मं वैविधातव्यं । तन्मुद्रा शिरादन्ना । ईशान
ईश्वरेदैवेन्यासमार्गेण देशिकः । कई लीकरणं यजेन्मूर्तियथा पुरा ॥
न नत्वा

यो मपपदलेष्पर्चेदक्षिणाद्विजैर वानू । पक्षे । णो पुष्पडंगानिक्रमेण । अर्च
येत्सुधी ॥ पूर्वादि ज्ञानपर्यन्तं तद्बहिः प्रजयेदिमान् । डाकिनीपुत्रकान्प्रू
र्वे शाकिनीपुत्रकान्प्रुनः । लाकिनीपुत्रकान्पश्चा काकिनीपुत्रको
स्ततः । शाकिनीपुत्रकान्भूयो हाकिनीपुत्रकान्पुनः । मा जिनीपुत्रका
न्पश्चाद्देवीपुत्रांस्ततः परं । अघोमारुद्रमातृणां पुत्रान्रुद्रा । हीण तोय
जे न । कुर्यात्पुष्पा मुना रुद्रमध्येसुरव्या स्मृतान्धः ॥ इतिमं प्रजयेत्कं ज
पुत्रकर्थायं यो दृशा । तद्बहिः षण्पत्रे पुलोकेशा बटुकान्यजेत् । अ
ग्राणीमंत्रकं पूर्वमाइशीपुत्रमीश्वरो । वैष्णवीपुत्रकं सौम्ये । कौम
री पुत्रमानिजे ॥ त्वं दाणि पुत्रकं न्यप-पश्चिमे प्रजयेत्ततः । महालक्ष्मी

न्नं पश्चाद्दशोदिशीम मर्द्दयेत्॥ नाराचीपुत्रकं यामं। यामुंडापुत्तमानले।
बटुकानूद शद्दिवज्वेद्धेतुकं त्रिपुरांतकं। वैतालं बंहि जिह्वाके रथं शालं
तानयं करालकं॥ एकपादं नीलरूपं मवल्दोटकेश्वरं। दिग्दिग्दिक्षु नराले पु
श्री कंबादीनू यजेत्तुनः॥ क्रोधीश्वरादीन् न्यस्तं तान् ग्ध बाह्ये ममर्द्दयेत्। न
तस्त्री जकुव्यी ग्राद्यानद्दलिता पूजयेत्सुधीः। दिव्यांतरिक्ष भूमिष्ठानं यो बटु.
गीशानूक्ष किसंयुतान्। यो गिनीः फड्डा भवेद्दीशानाग्नि निर्ऋतिषु त्त
नाशतिसंभऊयो देवं बटुकं प्रोक्त व त्सर्ना। धर्मार्थकामम्भो त्ताणं प तिर्नव २
तिमानव॥ विघ्नं दुर्गास्मिमाराध्य बलिं दद्याद्विधानतः॥ कान्यानि साधयेन्मं
त्रीयथोक्तं सिद्धिमाकुयात्स्व साध्या त्रपजलंमत्पिल्ला उद्भूतं निशार्ध

रा॥ गुडमिश्रुरसाज्यैर्मधुलाजैः पर सिद्धिनैः॥ हस्याकमन्लमाराध्य देवंश्रा
गुक्कवर्मना॥ रक्तचंदन पुष्पाद्यै निवेद्यास्मै बलिं हरेत्। ततः सिध्यंनिका
यी त्रि व जिदानेन मंत्रिणः॥ कुकुयाश्च पिवामंत्री यथोक्तां सिद्धिमाप्नुया
तां वश्याय कुकुयादिक्तु ग्राकजैर्वशायेऊजनान्॥ कुकुयात्युत्रजा ना
य प्रफुल्लै कैर वैः सुधीः॥ धनधान्यादिसंपत्तेरकुकुया रिलतनं उत्लै॥ बि
ल्वप्रसूनेकुकुयात्स हुर्मी विंदतिश्रियं। लोणेर्मधुरसांमिस्रै र्वशयेद्द निशा
न्नतान्॥ वृष्टिकामेन होतव्यं ते तमस्यद मसिद्धये। अनेन कुकुयान्नित्यं
धनधान्यानि मंपदे॥ वश्यायकुकुयान्नं चेमधुनादिवश्यं। रोगो
पद्रवशांतिकेन होमेन न रोगं न्यश्यति तत्क्षणात्। तन्त्वा फ्ता इस्यइडद्दोहन्लता

पञ्चमारसंतवे। या घृताक्तेन मत्स्यमांसेनो कुकूयाद्युतं निजैः। भूनादयः प्रजायं
ते नेक्षंते तेनां दिशं तयेत्। कृष्णाष्टम्यामारभ्य यावत्प्राप्नोतु चतुर्दशी। तिलैर्मांसं
जसं मिश्रैर्मधुरत्रयलोलितैः। भिक्षाप्रसं ज निर्दिनं। कुकूयात्सम्यक् नेत्रं निलो। व
टुकेश्वरं स्तम नन्यच्छेद्रोदुनोऽरफजान्वितैः। नित्यं निवेद्य नैवेद्यं मध्यरात्रे
बलिं हरेत्॥ ए वंकृपिवाञ्ययतः सद्भक्त्या एकैकविंशति पामा। सूदिवसेरात्रौ
चक्रं कुर्याद्बलिं हरेत्। ततः कारयिता राजा नो भयेभ्य स धनैः॥ विधिना बटु०
नेन संतुष्टो बटुकेशः प्रयच्छति। तेजो बलं यशः पुत्रा नृको निल्लेह
मरोगतां। नरुपंक्तिशात्र दाः सर्वे वर्द्धने मित्रबांधवाः॥ अथ वश्ये द्वेषनजाये २
न विद्यये न विजयेतस्य नृपतेः। कुकूयात्केवलैर्लोहैर्युतं समनने।

या॥ निगडादिविमोक्षाय प्रयोगोयमुदाहृतः। वचा कुष्ठं विपलं कुम्भे
गव्ये नाज्येन लोलितं। विन्नजानन्हायेछ्यं ध्यामंडलं पुत्रकांक्षिणी
विनीतं पुत्रमाप्नोति मेधारोग्यबलान्वितं। विन्नजानन्दपयेछ्यं ध्या
मंडलं पुत्रकांक्षिणी। विनीतं पुत्रमाप्नोति मेधारोग्यबलान्वितं।
श्रावणे तु प्रयोगस्य बटुकायबलिं हरेत्। द्विविधो बलिराख्या
तो। राजसः सात्विको बुधैः। राजसो मांसरक्ताद्य। फलत्रय
समन्वितः। घृतपायससंयुक्तो मधुरत्रयलोलित॥ सात्विको
मांसरहितः क्षेत्रपस्य तु रोचकवत्। अल्पणो नियतः शु द्वि:

पास्विकं बलिमांडरेणासम्च्चयेनमनुनानेन तस्मात्सर्वार्थसिद्धिदी। उशीरं
चंदनं कुष्ठं घनसारं मकुंकुमं। श्रीवार्कमूलं वेवाराहुंती नदमी ह्रीरमह्रा मह्रा। कंद-
वसो श्रिव्हिनरो मूलं शोषयिवा मुद्गमयेन। ब्रह्मदंडी। भृंगराजेन गोमये
ना विमिश्रितं। कृत्वा पिंडानि संशोष्य संस्कृतेऽर्धवाहने। मूलेन दद्यात् अ
ग्निमध्ये पत्रे वा विनिक्षेपेन। केतकी मालती जुव्हेवा मयेनम्मवृत्तं। अ
युतं ध्ज पेन मंत्रं मृष्टा सम्यक्तु हजितं। एतदाशायदीनशः प्रातः पुंदुं करो
तितियः। तस्य रोगाः प्रणश्यंति कृत्वा क्रोधा महाप्रदाः। रिपुचौरमृगाद्य ७
त्पातं यमसम्भवं नजायते। वर्द्धते सम्पदः सर्वाः स्फुरं ते सकले जने। रा
जावश्यो नवेत्तस्य समामात्यः सपरिच्छदः। श्रीलिपिकंबकवेतिराज्ञो दि

नयकोऽक्षिताः। सर्वोत्कमंडपे अभिषिक्ता नघकुंडकालिने। सर्वतो नदमा। तिलय
कर्णिकांतस्थसत्रयेन। अष्टशोताः प्रमाणेन आजिनिजेता नैःस्यतेः। तदर्द्धं तं
डुलांतस्यै न्यसात्कलकादिनामभिः। हेमादिविद्रुमं कुलं नवरत्नसमन्वितं। स्फोटा
प्यधिमत्तैश्चाग्नेयराशयो मित्रा निक्षिपेत्। क्षीरद्रुमप्रवालानि लक्ष्मीदूर्वास
तं पुनः। कर्पूरं चंदनं बिल्वं मुरारिं कुंकुमं पुनः। कंकोल मगुरुं जाति माद्विका
चंपकोत्पलैः। गोमेद्दहा हिमं पश्यतः सर्षपुग्गैन वेष्टयेत्। ताम्रेण वल्लाव
डकं। सकलं संप्रस्तरयेत्। त्रयोदशासु कूले पुत्रयोर्ह्रागगणान्नयजेत्। बाह्ये
दशासु कूलेषु लोकेशान्नर्चयेत्सुधीः। नवद्विदृष्टि कुंभेषु श्रीकंठादीन्सु
रेश्वरान्। पंचत्रिंशाद्घटे घर्चे क्रमादिवर्णे सुरान्क्रमान्। दतिगंधारादिभिः

सम्यक्रूपं वा वरणमर्चयेत् । अयुतं त्रयं होमं कृत्वा नान्ये घटानन्दे । श्रीकोनमः ॥ पा
यसैः समर्पितावाः सिद्धैः स्त्रीलैर्देवता ज्ञानं पृथक् ॥ कृत्यानां न घटानस्तु हुत्वा चतुर्दु ब
लिमाहरेत् । राक्षसो कंसकारेण राज्ञो देवीकमलनमश्मु दिने ज्ञोननेल्लये वा य
यित्वा द्विज न मनिः ॥ स्वस्ति मंगलवाक्यैः । नितिम्यु रूद्रैर्वेद पारगैः ॥ नदस्तु पंचवर्णैर्दो
ष्युपलब्धं बहुकेसरं । इति ते द्वियंस्तु वकायं राज्ञानं ब्राह्मणप्रियं ॥ आस्तिकं सत
वचनम लिखितं समन्वधीः ॥ अतिविक्तो नृपतिः प्रणिपत्य गुरुं परं । नृयमं
ह्यसितां दद्यात् प्रसीदतिय यमात् पुनः ॥ राजा । निधि कोष वनिमा द्वादश भूमि पुरंदरा ५
पराश्रितः पतेत् पानं स्तूयतो सकलैर्जनैः ॥ कृत्वा निष्कं च पराभो संड्रतिमा
संमद्दीपतिः ॥ न तु रंजो धिवलयां शास्त्रिमतां विस्तुं धरां ॥ गजाश्वत्वां निवि

येन वांछितमनुसाधकः ॥ कर्त्तव्या विधानेन होमं कुर्यान्नयथाविधिः पाय
मा स्यात् नित्यैर्विद्वान् अस्तु तत्रिनयाविधि । ब्राह्मणान् नोज येत्रित्यं न दक्षिणा
फला । दक्षिणः । बाकुम्भो काविधिनाकुं जानुमुखपायिनां । त्रिदोषीकः ॥ अथ सर्व गंध
पुष्पादौ कारयेत् सोमाय लडा न । अश्विनामा नामनेनैव वर्द्धते ते दिने दिने । यु
द्वे शुभहृत्तीना किमायते सर्वतो ऽधिकां ॥ सर्वरोगाः प्रणश्यंति तत्पाद्वो इह पदैः
कृतः ॥ अस्मात् परतरा रह्मा नास्ति तेषां महीतले ॥ निर्धि यामद्वीपालप
रेपाविद्धयोत्तनं । तुरंगनाविधिनामंत्रीया । निन्याबलिमाहरेत् । अनूनं
गामं हुत्वा । तह्माज्ञांहदीरितं । बलिजव दानस्स मये रिह्मणी सर्वसैन्यकं ।
निवेदयेद्बलि त्वेन बहुकार्याय विजोह धीः ॥ विदर्भयेचुनाम्मा बलिमंत्रं

तरामृधीः।रात्रूपस्तम्भकः धिरं पिबन्नितं च दिने दिने। नरो यस्य गणैः माईमार
मयम मन्तुं। बलिमंत्रो यमाख्यातः सर्वेषां विजयप्रदः। अनेन बलिना हृ
ष्टो बटुकः परिसैन्यकं। सर्वंगतोन्यो विनश्यैत्। मिषं कुर्वमा नमः एवं स नेप
र तले स्थीयते ना च मंत्रायुधं विजयश्रियमेनेनरा ज्ञा प्राप्नोत्यय न्ततः॥ श्रीमा
यामस्तकं मंत्रावि लिखेत् मध्येदले षट् सु। ह्रीं ओं कं बटुकायत्वामपद
रान्मेस्तम्भवश्यं। ह्रीं॥ अथ हं हं दले ष्टनत दक्षिरवत संख्या पत्रेषु षट्। दा
विंशाद्दलकां नमां। ति मद्दिं नं यंत्रं लिखेत् कुंकुमपुरे। आपदुद्धारणं यंत्रमपह
त्फलयापदुं। सर्वसंपत्प्रदं नित्यं सर्वसौ। ख्यप्रदायकं। घोर दारिद्र्यशत्रू
नां मक्षा विजयवर्द्धनः। आपदुद्धारणाद्भ्यासात् पदुद्धारणे हीमः। मं
त्रेषु नाम्नी मंत्रो न्यद्दत्याकुम्भत्र वेदितः॥ ॥इति बटुकभैरवस्तोत्रं॥ ९ ६